DPN 5923

Title : दशबल स्तव स्तोत्र DAŚABALA STAVA STOTRA

Run. No. 6614 Cat. No. Micro. No.

Subject स्तोत्र Hymn Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 20.5 × 8 Folios 8 Lines (in a page) 6

Compl. / Incompl. Chapt. / act /

Author / translator Scribe / donor

Date: NS / SS / VS / KS Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

निरयजन्मसमानिमनसकातं जथमा ।। नयदत्सनमाचैयतां ।। २३ ।।

ग्यादमनुद्भगमूढवादि । नागयज्ञागसमाक्षुरवादि ।। ३ ।। प्रंसर्द्धोऽद्वति
ममवोधधं । प्रणपोविविधंजविरर्ह्मघा । जनं उकूलावायिकर्ह । दगि
सवताया ल्मिसमर्थ्या ।। ४ ।। माद्दत्पदिनःगनर्द्दतु । त्वंमसादमकादधि
सकृ । यमिकृत्वथ, यनवाक्ष । त्वंप्नुद्वंमानिगकलवाक्ष ।। ६ ।। दगिगम्
गमानृर्कवनद्व । र्व्यावदिमक्रःडखिकसर्वं । निर्जितइर्य्यंअत्रमाणवा । त्वंस
वीप्लुखधानवयार्द ।। ६ ।। सकलग्रामननिर्जितं द्रः । त्वंयविसमद्धि द्र

गगसदहा ॥ रागवननुयमकानूलामिधू । लंजनविकिमाकानूलावधू ॥ २० ॥
सीलाविदविनकर्णूविरागा । लंयवहुदविबयवधासंया । दिव्याध्यातसमाधि
गविलं । लंनावक [illegible] ध्यावननिलि ॥ २१ ॥ यचमूयकूवनिविकनूलावा । मः
धियनिगावनक [illegible] गेराबी । कथमिकमाकमहायगद्दह । विषयसमिदाकुग
लंरावमा ॥ २२ ॥ सकलजनाथप्रतियाकनूला । गाविरावतानियमनवः
लना । जननवन्धसिद्धिमिमवन्धं । रागवनयूरमामाविरूवन्धं ॥ २३ ॥ नाथ

वृश्रानव्या । मविसारा । सर्वस्वजर्थावूदजलधारा । थलजननिम्नाननवङ्गदग
सनमिनवंनवमविगमलोवं ॥ २४ ॥ कृकिरागवनक्कवतनीपिजर्यनयम
मगनदी । जगद कु [illegible] गी । शीयागम [illegible] श्रीविवासी । [illegible] नमउसदवाविधिथविः
वासी ॥ २५ ॥ [illegible] गाज्ञा [illegible] नलाकि [illegible] म्धनस्य । ववयागियाविवावित । गवगा
गसमाप्ता ॥ [illegible] ॥ ॐ नमो साकनाथाय । स्तुत्वाग्र लभ्यमरयं । कलसवेस
ला । संपूर्णस्वेद्धवदनीवजयगनग । सर्वकक्कानमकूदा । कूरामूक्तिमागं । संय

मयाजिनवरंशिखिनंनमामि ॥ १ ॥ उत्तुंगनागवरपीनवाद्यानसक्तौ । मे
कीर्धवंद्विमजुषाचमिवासुदेवी । वभ्राग्वरंगुणिधनमिधूवंवदार्थः । तंयमया ः
मिमृदुवल्लभिवन्नमामि ॥ २ ॥ मानावधर्मकानकचलविशुविभागि । नगुणयक
टविशुमिनवालवंद । क्रकुछ्रजिनावलधवायसवर्ज्जितंबु । तंयमयाजिनवराणि
तनूंनमामि ॥ ३ ॥ त्रैलोक्यनाथमवलोकितनामधेय । दलायविततदर्शवल
सयनाद । विंशि[illegible]मदिप्रवरकृतसंघसंगं । तंयमयाजिनवरानि सर्वदेहनंनम ।

मि ॥ ४ ॥ वंदे[illegible]नामि तथाजितपूर्वसत्वा । संसारयकनिमिवाश्च यमसस
ख । ज्ञानाकेतपथमनूकनवातिमार्ग । तंयमयाविजनवनमार्गदर्दनमामि ॥ ५ ॥
॥ गताचयननरकपूजाविविमग्नी । गीतिहं । नंददिविगालनकंसयदर्श । यनानः
क्रिसवनसइखविना यन्कि । तंयमयाजिनवराभिसमंनमामि ॥ ६ ॥ संसाराम
यंतियमयावधाराम्नतुमि । धर्मरत्ना[illegible]मिव आगतवामनूपि । यकम्मेरत्नमिमिव
धींसिमदानिभिरत्नं । तंयमयाजिनवरशासनमतनमामि ॥ ७ ॥ उत्वावयनवरं

ममनादनाय। त्रैलोकनाथजगयसकलसर्वसत्वा। दुःखार्णवेनिपतवस्मयामिमिमग
क्लिशर्वं। तंप्रणमामिदननाकविभु नमामि॥ ८ ॥त्वंप्रतनाशगगतयकारुण्य
वसन। सुविमुखदिदलयवनजितमीग। दृढदुःखविपित्तिजगतीनरुवा तुरानांनि
यप्रणमामिरत्नसकलनमामि॥ ९ ॥अर्भ्यान्यजरूजधर्मविनशुमसत्वा
संधीयतवानृगोजयवत्नदीशिश पूर्षिमनांमहरवूजहमा तुरानां तंप्रणमा
मिदतरत्नकरुणानमामि॥ १० ॥गत्वाकर्मरत्नवनवजितमन्दुरहद। चिंतामु

णिकलितनवपराक्रमरास। गजश्चवाश्वसगलिश्ववनेनमस्तु। तंप्रणमामित
मरत्नकरीनमामि॥ ११ ॥गत्वाचर्यनवलिरत्नमनाचथमा। जदियगरुल
मनुजवयिगुयापी। धर्मकोव्थनयविगगिमदानवर्ह। तंप्रणमामिवनधर्मदद
नमामि॥ १२ ॥गत्वाचर्यनदिविक्षीतलदनयूता। दानस्यदानजप्रयीतिग
दुःखिनवि। त्यावयन्तियविश्चलसमृद्धिनलं। तंप्रणमामिनवृद्धिदर्वनमामि
॥ १३ ॥नष्कामनुयमुपदभिगायाकमिशिक्षकामावसनवनिमंगवनाकर्म

रिष्कघ॰ कृस्यविलयाविवर्जितधर्म्मविलं। तंयमयामिशिवकल्पतरुंप्रणमामि॥ १६॥
विहृमृगरत्नमिश्रमिवाढ्यसम्बकवन्हि। गन्धवयनेत्रज्वलितकृपया नासमवन्हि। निध्या
निर्मधूनघनायक्षदीपितभर्गं। तंयमयामिशिवकल्पतरुं प्रणमामि॥ १७॥ हरि
कमामेन्दुनेत्र॰ ॰॰ चपपुष्टि। कोपीकृत्य स्वरूपवि॰ गुणदैसत्वा। धान्यादिह
स्थितव॰ शो॰ ॰॰ह्वदिनतं। तंयमयामिशिवकल्पतरुं॰ ॰॰ नमामि॥ १८॥ बाल
कृत्यध्वहृणादपमसंशयजावन। डक्कुमयेनविलिडं॰ यनाकसीति। ओंस्कन्धं॥

मदनबलविजेतु। वायथाद्भदवातु। फितुनदिविकनु। स्मीनवीणासर्द
ध्यास मस्तवकलनाथु। शन्तुवक्तानगेवी। दशबल ॥ ३ ॥ मस्तुनतुव
नवासी। मगजन्मागहेवी। सकलस्तुलभाना। लोगप्रष्टीवागहृ ॥ स्वायेत
मनुजवासी। अकायानिस्वयीतु। दशबल ॥ ४ ॥ उद्भयमिविगनद
स्थु। विश्वमवदशामी। किमियमिकालहना। वश्वकपुडानां। नविषयिमदः
लालेलि। सर्वथासायिसफा। दशबल ॥ ५ ॥ द्विवदगनयाडु। गीमसभी

सगाधिा। कालिमङ्ं बेनजन्या। सर्वभूजामलिङ्गो। अविगतमदयाग। सर्वथासा
यिस्फा। दशबल ॥ ६ ॥ घवनतुडवतुस्का। थ्वातुमाधाअवका। जय
नियमकलीया। गामवदयवक्ता। जुनलकमलयानि। सायिवक्तायसफा। द
शबल ॥ ७ ॥ हिमगिरिशिखवीरा। सयजिह्वाप्रविनी। त्रियूवदहनदक्षा।
मागप्रदर्शी लेवीय। सदगीशिवीवपूत्रा। सादिस्फातिगुरी। दशबल ॥ ८
॥ कलिमकुलिसपालि। हजेयादानवानी। सवयानिवदिसचा। दियमाष्टु

रवेणा। जुदिनसिगभिसुपा। [illegible]मर्यौकाविग ग्रा। दगावल ४। ९ ।
कुवलयदलनील। कुन्तुलिकां[illegible]। [illegible]सिन्दू[illegible]तैला। विम्बफलाद्दिव्यरूपी
ला। [illegible]वीरयिविर[illegible]। गरुडवासेनमुक्ता। दगावल ४। १० ।। कालिगजगतकुला
या। नक्षत्रमाला[illegible]। यमुयोतिषनिकालासंग[illegible]सादका। स्मवगद्दालिनी
ला। साधिसप्ताङ्गलासा। दगावल ४। ११ ।। हिमगगिकुमुदाश। मघवा
ना मूर्वाक्ता। हरदर्थिनजुडीणा। [illegible]गारगोकि[illegible]। वलाङ्कदगायितली।

रवकिकाण्डवल्ला। दगावल ४। १२ ।। गजमुखदगानया। सर्वभविघ्नहला
जुविगतमदवालि। मत्यदागीमगलु। गनयमिरयिसुका। वासुकियानमङ्
ला। दगावल ४। १३ ।। जुलसिकुगुमनिला। [illegible]। नवनलि
पया। धैसरबक्षीवद्दला। त्रिनयनमननथासो। साधिसकाकुमारी। दगावल ४।
[illegible] ।। [illegible]नवगनदिला। नि[illegible]। [illegible]। पुराद
[illegible]। [illegible]यगलिक्षीना। सयिनमनायसक्का। दगावल ४। १४ ।

अथयङ्गनसाका। तर्सहंगाविनाया। जगदूतर्दगिस्ह्र। थ्यासवामीज्ञावर्गी
।युवतिजघणगका। भाङ्गिनास्कयिस्फा। दगवलर॥ १६ ॥जगवनूण
कुवला। रुक्ङ्दंष्यान लीडा। देविसुंदवेगनवा। लाकयासास्कथान्य। युवतिमद
मदाक। वीङ्गिनास्कयिस्फा। दगवलर॥ १७ ॥तवकजलधिनिमग्ना। मोह
जासारुनीभी। मूनिकयिलकनाथा। तमितामृडवना। समस्तखरुलकीना।
वालीनास्कयिस्फा। दगवलर॥ १८ ॥अज्ञाननिद्रुलजनी। तमसिपस

का। दुष्ट्रविगालसयन। विषयाप्रधान। कालस्तूतागुरस्ले। यचियलेमान। जा
गतियसमनमवनमाःस्युनस्ये॥ १९ ॥तीर्थ्यवलोकुलसता। नियिवाल्कगा
यी। दुष्क्रिवर्दनिवव। क्वायमपुर्यातिगन्द्दमूनकाविगते। वचिसंयुमस्य। नको
यगुणनिधि। गुणसागरस्य॥ २० ॥सूर्यरातनवेकस्यज्ञानाभिनवङ्गय
अज्ञानतिमिराथानां नित्यमस्तुस्त्रिपानवि॥ २१ ॥
॥ २२ ॥मूनष्यरातयनमुस्त्रिणानवि। पूनष्गगीकादूनष्ववसवनी। मूल

उवाडाल्म तल्वेत्रहुया । गगागतिमूढवाथं । विबुद्धस ॥ २२ ॥ म्नत्ररतनम
नकगी । श्रियपित्त जिनत्रियी । बुद्धंधर्म्मंचसंघंच । प्रनमामिदिने दिने ॥
२३ ॥ स्कंध्वामाथवनचुं । महामुनिवरं । सवमेपूआवर्य । निदग्धेरुनवाग
धयसाधि । [illegible] यनिरोधं । जयुन्यसमूयाजिनी । खलुम धामनंदलाको
दल । [illegible] दवेता । दगवल गंद्धामग्रवामाप्नयात ॥ २४ ॥ प्रायश्रीव
ध्वननवस्य । दगवलक्यगतसमाप्त ॥ ॥ श्रीजिनीश्रीदबंधवस्य

॥ नमो बुद्धाय ॥ [illegible] यकगमग्नस्य । संसारावारमहादत्थं । यविक्लाखा
मनुसमं [illegible] कलथागतं ॥ १ ॥ निमिग्गोलखविताडौ [illegible]
वादितौ । [illegible] आदिमाकलथागतं ॥ २ ॥ [illegible]
[illegible] आदिमाकलथागतं ॥ ३ ॥ [illegible]
यायक्तिजना [illegible] आदिमा [illegible] थागतं ॥
४ ॥ श्रीकृत्यमहाशाल । नवयादवसागरं । [illegible] आदिमाक